M. T. B. COLLEGE, SURAT

Manuscripts Library

No. Ref.
Ser. 957

Title: Ardhodaya Vrat
(Skand Purana)

957

Complete

Ardhodaya Vrat – Skand Puran : Title

: Author

: Editor

: Year, Vols.

: Publisher

957 : Remarks

अर्कोदय

॥ॐ॥ ॐ नमो गणेशाय॥ स्कंद उवाच॥ देवदेव महादेव ब्रूहि मे वदतां वर। पापक्षयकरं नृणां। कस्मिन्मासे कलौ
युगे प्राप्ये साधुः स्त्रीनामर्त्यैः प्राकृतैर्गुणसंचयैः। कथं तु संस्कृतं तत्र यन्नारं तद्वदस्व मे प्रभो॥२ यदि कश्चिदु
पायोस्ति तन्मे ब्रूहि सुनिश्चितं। ईश्वर उवाच॥ शृणु वत्स प्रवक्ष्यामि सर्वपापप्रणाशनं॥३ सर्वकामप्रदं नृणां
उपायं निश्चितं मया। माघादौ तु कृत्वा व्रतं शेव वर्णकैर्भ्रातर्यदि॥४ यायात्तत्रैव तृच्छतीपातः सर्वपापप्रनाशनः
श्राद्धोदयः स विज्ञेयः सूर्यपर्वशतैः समः॥५ तावद्गर्जंति पापानि सब्रह्मघ्नानि महान्त्यपि। यावद्धौदयान्वे
ति सर्वपापप्रनाशनौ॥६ श्राद्धोदय समायात पुरुषाश्चैव तैरवरतु। सर्वान् समुद्धृत्य स्नात्वा व्रतं कर्तव्य ज्ञानि
तु॥७ श्राद्धोदयादिस्तत्फलः स्याद्दश लंघितो स्त्रवेतु। प्राकृतैर्मंदस्त्वागोप्य तस्माद्दिव्यानि सकृतं॥८ जन्मप्र
भृति यत्पुण्यं पुरुषैः समुपार्जितं। तद्दहेन्नाशमायाति। लंघितस्मिन्न्तु व्रताते नमो॥९ श्राद्धोदय महा
पुण्ये सर्वे गंगासमं जलं। सर्वे काशीसमं क्षेत्रं। सर्वे विप्रास्समाद्विजाः॥१० श्राद्धोदानेच कर्त्तव्या ग्रन्थया
न दिव्य एव सुरवः। तत्र्यान्नानि देयानि तत्र व्रतानि भूचतीनि च॥११ एकस्यायमत्यो। सो स्वर्गादि फलकाम्यया
कलापुरप्रदोयस्तु सदा शिवपुरं व्रजेत्॥१२ हिरण्यगर्त्तोदाम त्योत्तत्रवे यासंनगच्छति। स्कंद उवाच
श्राद्धोदयादिकालोमन्त्योमंदत्ताख्यामादहर॥१३ श्रुत्वा क्याच्चमिदानाद्य मुमुक्षुतकिं व्रतविधिकथं। ईश्वर उ

वाच। कथयिष्यामि तत्स्कंद व्रतस्यास्य विधिं शुभं॥१४ श्राद्धोदायव्रत्या कार्ये नरैः पापापनुत्तये। नृत्य
स्य एकैकमुख्यं तदा हेमशुमत्तावतः॥१५ दशविंशति नित्यं चायपल विंशतिरथवा। एवेसु घटितं कार्यं कांस
स्य जाड्यनेयुक्तं॥१६ निभयथ्यायमेतच्च तन्मात्वा च्छ्रद्दलं लिखेदं त्राप्रद्य स्थक्रमेकार्यांत कर्षमात्रं।
सुवर्णकं॥१७ तदत्तावतनदेवात दर्भे चाथ निःक्षिप्य तु। सुवर्णकं सैकामाध्य लिंगं तत्र वै कल्पायेत्॥१८
पंचामृतेन संस्नाप्य वेदानसु गंधिना विलिप्य विधिवद्ध्य प्रपूजीत तत्र प्रकल्पायत॥१९ पुष्पैः सुगंधि
लिंडचिरात्रा कैः कालसंस्तवैः। नमः शिवाय मंत्रेण पूजां निवर्तिते न्नक्तितः॥२० धूपैदीपैश्च नैवेद्यैः
कर्पूरीचं नाम्विते। नालिकारिणराम्यनादद्यां दद्ये विधिनतः॥२१ वस्त्रयुग्मं रलंकृत्य तं विप्रा
य प्रदापयेतु। अन्नं ब्रह्मा शिवेदमणं शेष वै जनार्दनः॥२२ तस्माहेतत्रयं देद्यात्तत्रयीमयं दिव्यं जनं
। सुवर्णपायसे पात्रं। तस्माद्देतत्रयीमयं॥२३ नव्रजिनारा कास्मा कं व्रत दान द्विजान्नमः इद्य
श्रीयदि देवं तत्क्यानमस्कृत्यदमायपयेत्॥२४ एवं यः कुरुते दानमाद्वौदय महातिथौ सर्वान्नू कामा

नवाप्नोति प्रासादान्मनष एत्तुरवः॥२५॥ गावर्णमात्रां भूमिं वा दद्याद्वा द्दोदायतिथौ॥ सदक्षिणामानवा

प्नोति नावयथाशक्त्यायाद्ददाति वस्तुंधरां॥२६॥ चक्रवर्त्ती भवेत् राजा कार्त्तिकव्रतसंश्रयः॥ ष

ड्डोदायः स्तुरत्नौ स्वादस्त्री सदक्षिणां वस्त्रयुतां वस्त्रयुतां स वज्ञको सालंकृतां द्विजपुंगवाय॥

सयाति दद्यात् शिवालोकमक्षयं॥२७॥ ग्राधागतिगतान्यवा बकुणपापानि संकटात॥ तिलपात्रप्रदाने

नातानुदरतिसंकटात्॥ षट्द्वोदायसः सुवस्त्रवसे वस्त्रागादानं दानाद्विजपुंगवाय श्रुजत्वमिद्रा

वमहीपतिर्वै संशाप्य गावास्ति शिवालोकमक्षयं॥२८॥ एतन्ते कथितं सर्वं तव प्रीत्या द्विष एत्तुरवः सु

तपापहरं पुंसां कलेः किं कथयाम्यहं॥३०॥ इति श्रीस्कंदपुराणे श्राद्धोदयव्रतं समाप्तं॥ ८

हिरण्यभूमि आन्यानां दानं विना तु स्मारके॥ तान्यथं श्रद्धयोपेतं ब्राह्मणेभ्यः प्रयत्नतः॥ ब्रह्म विष्णु महेशानो

सुवर्णपिजर्य स्थायां कर्त्तव्या बालदर्शनं न दर्घाघो नवाप्तुनः॥ मार्गशनत्रयी शीलो जो णानां निजपर्व नः

कर्त्तव्या॥ विष्णुरुद्राणां श्री पूर्वोक्तसैरव्यया॥ तेषां मग्रे प्रकल्प्याग्ने ब्राह्मणेभ्यः प्रदापयेत॥

श्री व्यांमोपस्कुरां दद्यान्नू मार्गशरमयी इत्यं